

सामुद्रिक

जिसमें

पुरुष और स्त्रियोंके शिरसे लेकर चरण पर्यन्त
सब अंगों के लक्षण, वीर्य्य, रक्त और हाथ
की रेखाके लक्षण, स्त्रियोंके अशुभ,शुभ,
उत्तम, मध्यम और रानीहोने के लक्षण
इत्यादि अनेक विषय वर्णितहैं ॥

पहलीबार

19

लखनऊ

मुंशीनवलकिशोर (सी,आई,ई) के छापेखाने में छपी

अक्टूबर सन् १८९६ ई० ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

सामुद्रिक ॥

आदिदेवंप्रणम्यादौ सर्वज्ञंसर्वदर्शनम् ॥
सामुद्रिकंप्रवक्ष्यामि शुभगंपुरुषस्त्रियोः १
पूर्वमायुःपरीक्षेत पश्चाल्लक्षणमेवच ॥ आ
युहीननराणांच लक्षणैःकिंप्रयोजनम् २ वा
मभागेतुनारीणां दक्षिणेपुरुषस्यच ॥ निर्दि
ष्टंलक्षणंतेषां सामुद्रवचनंयथा ३ पंचदीर्घं
चतुःह्रस्वं चतुःसूक्ष्मंषडुन्नतम् ॥ सप्तरक्तंत्रि
गंभीरं त्रिविस्तीर्णंप्रशस्यते ४ बाहुनेत्रांतरं
चैव जानुनाशास्तथैवच॥ स्तनयोरंतरंचैव
पंचदीर्घंप्रशस्यते ५ ग्रीवाथकर्णौपृष्ठंच ह्रस्वे
जंघेचभूपतिः ॥ ह्रस्वानियस्यचत्वारि पूजा
प्राप्नोतिमानवः ६ सूक्ष्मान्यंगुलपर्वाणि के
शास्थिदशनास्तथा ॥ पंचसूक्ष्माणियेषांच
तेनरादीर्घजीविनः ७ कक्षाकुक्षिश्चवक्षश्च
घ्राणस्कंधललाटिका ॥ सर्वभूतेषुनिर्दिष्टं ष

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

डुन्नतप्रशस्यते ८ पाणिपादतलौरक्तौनेत्रां
तानिनखास्तथा ॥ तालुजिह्वाधरौष्ठंच सप्त
रक्तोर्थवान्भवेत् ९ उरःशिरोललाटंचत्रि
विस्तीर्णंप्रशस्यते ॥ स्वरोमनश्चनाभिश्च
त्रिगंभीरंसुखप्रदम् १० मुखश्चार्द्धशरीरश्च
सर्वंवामुखउच्यते ॥ तत्रापिनासिकाश्रेष्ठा
श्रेष्ठातत्रापिचक्षुषु ११ नश्रीस्त्यजतिरक्ताक्षं
तालुकंनवपिंगलम् ॥ दीर्घबाहुंनचैश्वर्यं नि
र्मांसोपचितंसुखम् १२ उरोविशालोधनधा
न्यभोगी शिरोविशालोनृपपुंगवश्च॥ कट्यां
विशालोबहुपुत्रदारो पादौविशालौसततंसु
खीस्यात् १३ चक्षुस्नेहेनसौभाग्यं दंतस्नेहे
नभोजनम् ॥ त्वचास्नेहेनशयनं पादस्नेहेन
वाहनम् १४ अकर्मकठिनौहस्तौ पादौचघृ
तकोमलौ ॥ यस्यपादौचहस्तौच तस्यराज्यं
विनिर्दिशेत् १५ दीर्घलिंगेनदारिद्रंस्थूललिं
गेदरिद्रता ॥ कृशलिंगेनसौभाग्यं ह्रस्वलिंगे
नभूपतिः १६ कनिष्ठांगुलिमूलाच्च रेखागच्छ

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

तितर्जनीम् ॥ अविच्छिन्नानिवर्षाणि शत
मायुर्विनिर्दिशेत् १७ कनिष्ठांगुली पश्यात्
रेखागच्छातिमध्यमाम् ॥ अविच्छिन्नानिव
र्षाणिषष्टिमायुर्विनिर्दिशेत् १८ रेखाभिर्बहु
भिःक्लेशं स्वल्पाभिर्धनहीनता ॥ रेखाचतुष्ट
येसौख्यं बहुरेखादारिद्रता १९ अंगुष्ठोदरम
ध्यस्थोयवोयस्यविराजते॥उत्पन्नभक्ष्यभो
जीच सनरःसुखजीविनः २० अतिमेधाति
कीर्तिश्च विक्रांतोतिसुखीतथा ॥ अतिस्नि
ग्धाचदृष्टिःस्यात्अल्पायुश्चविनिर्दिशेत् २१
महाकर्णोमहानासा महापादोदरास्तथा ॥
सुबाहुदृढनेत्राश्च तेनरादीर्घजीविनः २२॥

इतिसामुद्रिकेपुरुषलक्षणाध्यायःसमाप्तः ॥

अथापरंप्रवक्ष्यामि देहावयवलक्षणम् ॥
तत्रपादतलंयच्च यथासर्वज्ञभाषितम् २३ अ
स्वेदौपाटलौश्लिष्टांगुलीकूर्मोन्नतौमृदू ॥ उ
ष्णौताम्रनखौगूढगुल्फौपादौनृणामुभौ २४

इतिसामुद्रिकेपगलक्षणम् ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

सूर्याकारास्तथाभुग्ना वक्राःशीताःशि
रायुताः॥ सस्वेदापांडुरारूक्षाश्चरणास्तिवि
निंदता २५ नखैस्तुदीप्तिसंयुक्तैः संहतैश्चरणै
स्तथा॥ कूर्मोन्नतैश्चरक्तैश्च पुरुषाःस्युर्नराधि
पाः २६ अंगुष्ठौविपुलौयेषां तेनराःदुःखभा
जिनः॥ क्लिश्यंतेविपुलांगुष्ठास्तथावाध्वान
गामिनः २७ उन्नतैश्च समास्निग्धैरसितैः
सुखभाजिनः॥ वृत्तैरक्तैस्तथाताम्रैः नखैस्ते
स्युर्नराधिपाः २८ यस्यप्रदेशिनीदीर्घा अं
गुष्ठंचव्यतिक्रमेत् ॥ स्त्रीभोगंलभतेनित्यं
पुरुषोनात्रसंशयः २९ मध्यमायांतुदीर्घा
यां भार्याहानिर्विनिर्दिशेत् ॥ अनामिका
यांदीर्घायां विद्याभोगीभवेन्नरः ३० साचह्र
स्वाभवेद्यस्य तंविद्यात्परदारगम् ॥ यस्य
प्रदेशिनीस्थूला भर्तुश्चैवकनिष्ठिकाम् ३१
ह्रस्वाक्लेशायभोगायांगुष्ठादीर्घाप्रदेशिनी॥
समातुमध्यमाश्रेष्ठा श्रियेदीर्घा कनिष्ठि
का ३२ असंहिताभिरस्वाभिरंगुलीभिस्तु

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

मानवः ॥ दासोवादासकर्मोवा सामुद्रवचनं यथा ३३ अंगुल्योपिसमादीर्घा संहिताश्च समुन्नताः ॥ येषांप्रदक्षिणावर्त्ती पार्थिवास्ते नसंशयः ३४ ॥

इतिसामुद्रिकेपादांगुलीलक्षणम् ॥

नखैःश्वेतैश्चविक्रांतैः तेनरादुःखभाजिनः ॥ दुःशीलाःकुनखाज्ञेया कामभोगविवर्जिताः ३५ विक्रांतैःस्फटितैस्थूलैः नखैर्दारिद्रभाजिनः ॥ महापापानिकुर्वंति पुरुषा हारितैर्नखैः ३६ इंद्रगोपकसंकाशैर्नखैर्भवतिपार्थिवः ॥ ताम्रैर्नखैस्तथैश्वर्यं प्राप्नुवंतीह मानवः ३७ वर्तुलैश्चस्तथैश्वर्यं पुष्टितैःशुभगोभवेत् ॥ स्निग्धैश्चपरितस्ताम्रैर्नखैर्भवतिभूपतिः ३८ ॥

इतिसामुद्रिकेहस्तनखलक्षणंसमाप्तम् ॥

धनिनस्तुरजंघाया राजानोमृगजंघका॥ दीर्घायुस्थूलजंघाभिर्जायते ध्वानगामिनः ३९ सिंहजंघव्याघ्रजंघाधनकीर्तिप्रदायका॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

रोमयुक्ताचजंघाच दारिद्रंसपरिक्षति ४० शृ
गालसमजंघानां लक्ष्मीस्तेषांनजायते ॥ मी
नजंघःस्वयंलक्ष्मीः संप्राप्नोतिनसंशयः ४१
स्थूलजंघाश्चसूक्ष्माश्च श्रियंभुंजंतिमान
वाः ॥ उष्ट्रजंघानरायेच नित्यंभाग्यविवर्जि
ताः ४२ काकजंघानरायेच तेषांराज्यंविनि
र्दिशेत् ॥ दुःखेनकाकजंघाश्च जंघालक्षण
मुद्धृतम् ४३ ॥

इति सामुद्रिके जंघालक्षणं समाप्तम् ॥

एकरोमोभवेद्राजा द्विरोमोधनवान् भ
वेत् ॥ त्रिरोमःपंडितःप्रोक्तो बहुरोमोदरि
द्रता ४४ ॥

इति सामुद्रिके रोमलक्षणं समाप्तम् ॥

हंसहस्तिसमाःगत्या पुरुषाःस्युः नराधि
पाः ॥ वृषचाषशुकानांच गतिर्भाग्यवतांभ
वेत् ४५ जलोर्मिसदृशायत्रकाकोलूकसमा
गतिः ॥ द्रव्यक्षयकरीज्ञेया दुःखशोकभयं
करी ४६ ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

श्वानोष्ट्रमहिषाणांच खरशूकरयोस्त
था॥ गतिर्येषांसमाख्याता तेनराभाग्यव
र्जिताः ४७॥

इतिसामुद्रिके गति लक्षणं॥

दक्षिणावर्त्तलिंगेनसनरःपुत्रवान्भवेत्॥
वामआवर्तलिंगेन नरःकन्याप्रजायते ४८
स्थूलकृष्णंभवेल्लिंगं सनरोदुःखवान्भवेत्
प्रलंबवक्रलिंगैश्चपुरुषाःसुखभोगिनः ४९
एकैकधारलिंगेन नरोभवतिपार्थिवः॥ द्वि
धारैर्धनवंतश्च बहुधारादरिद्रता ५०॥

इतिसामुद्रिके लिंगलक्षणम्॥

मीनगंधेनशुक्रेण धनवान्पुत्रवान्भवेत्॥
हविर्गंधेनशुक्रेणगवाढ्योजायतेनरः५१मधु
गंधेनशुक्रेण नरः स्त्रीजनवल्लभः॥ पद्मगंधे
भवेद्भूपो महिगंधेनपार्थिवः ५२ लाक्षागंधेभ
वेन्निस्वो मांसगंधेनतस्करः॥ व्यसनीवचसा
गंधे मद्यगंधेनदुःखितः ५३ कटुगंधेनशुक्रेण
पुरुषोदुर्भगोभवेत्॥ क्षारगंधेनशुक्रेणनरोदा

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

रिद्रभाजनः ५४ पयोवर्णेनशुक्रेणभवेद्राजा
नसंशयः ॥ श्यामवर्णेनशुक्रेण देहभोगीभ
वेन्नरः ५५ ॥

इतिसामुद्रिकेवीर्यलक्षणंसमाप्तम् ॥

समपादोपविष्टस्य महीस्पृशतिमेहनम् ॥
सभवेद्दुःखितोनित्यंदारिद्रेणचपीडितः५६
समपादोपविष्टस्य गुल्फोस्पृशतिमेहनम् ॥
ईश्वरंतंविजानीयात् सुखिनंभोगिनंनरम्
५७सिंहव्याघ्रसमंयस्य हस्तंभवतिमेहनम्
भोगवांसुसर्वोज्ञेयस्तथातुरगमेहनम् ५८ ॥

इतिसामुद्रिकेलिंगाधिकारः ॥

अलक्तसदृशंरक्तं जायतेयस्यशोणितम् ॥
धनवान्भोगवांश्चैव सनरःपरिकीर्तितः५९
प्रवालस्निग्धरक्तंच शोणितंयस्यदेहिनः ॥
राजानंतंविजानीयात् देवतासमहाबलः६०
पद्मपत्रनिभंयस्य देहेभवतिशोणितम् ॥
जायतेबहुधाकन्यादुःखिनश्चसदाभवेत् ६१
गोमायुसदृशंयस्य श्वानोष्ट्रमहिषस्यच ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

सभवेत्सुखिनोनित्यं धनहीनोनसंशयः६२॥

इतिसामुद्रिकेरुधिरलक्षणम् ॥

विस्तीर्णाचकटिःस्निग्धा शुभापुंसांप्रशस्यते ॥ निर्मांसास्तिकटीवस्तोस्तेनराद्दुःखभागिनः ६३ सिंहव्याघ्रसमायेषां कटिश्चेद्दंचनायका ॥ रक्तेवानरतुल्याच कटियेषां नशोभना ६४ ॥

इतिसामुद्रिकेकटिलक्षणम् ॥

मृगोदरोनरोधन्यो मयूरोदरसंनिभम् ॥ मंडूकसदृशोयस्तु सनरःपार्थिवोभवेत्६५॥ व्याघ्रोदरोगजपतिः श्वशृगालोदरोधमः ॥ नरसिंहोदरोयस्तु धनधान्यसमृद्धिवान्६६

इतिसामुद्रिकेउदरलक्षणम् ॥

वर्तुलाचातिगंभीरा नाभिःपुंसांप्रशस्यते ॥ उत्तानाविरलानाभिः सदादुःखप्रदायिनी ६७ गंभीरेभूपतिकुक्षावुत्तानेस्त्रीमुखेक्षुकम् ६८ ॥

इतिसामुद्रिकेनाभिलक्षणम् ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

उन्नतौपचितौयेषां वनास्निग्धौपयोधरौ॥
सनरोमैथुनेशूरो भोगवंतःस्वकर्मभिः ६९
उन्नतोनैवास्निग्धश्च शिथिलौचपयोधरौ॥
निर्मांसौचकुरूपौचतेनरादुःखभोगिनः ७०

इतिसामुद्रिकेस्तनलक्षणम्॥

विस्तीर्णहृदयंयेषां मांसलोपचितंसमम्॥ शतायुतंविजानीयात् बहुलोमंमहाधनम् ७१ जानुंनिर्मांसलास्निग्धे उरुविस्तीर्णवर्तुले॥ इष्टकाभाकटीशस्या मध्यंतुकुलिशोपमम् ७२॥

इतिसामुद्रिकेहृदयलक्षणम्॥

सिंहपृष्ठोनरोयस्तु धनंतस्यविनिर्दिशेत्॥ कूर्मपृष्ठोभवेद्राजा धनसौभाग्यभाग्पुनः ७३॥

इतिसामुद्रिकेपृष्ठलक्षणम्॥

प्रलंबबाहुःस्वामीस्यान्नरःसर्वगुणान्वितः॥
ह्रस्वबाहुर्भवेद्दासः परकर्मकरःस्मृतः ७४॥

इतिसामुद्रिकेहस्तलक्षणम्॥

यस्यमत्स्यसमारेखाकर्मसिद्धिःप्रजायते॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

धनाढ्यस्तुसविज्ञेयो बहुपुत्रोनसंशयः ७५॥
आतपत्रंकरेयस्य दंडेशसहितंपुनः॥ चामर
द्वितयंचापिचक्रवर्त्तीसजायते ७६ स्वस्ति
केजनसौभाग्यं मीनेसर्वत्रपूज्यता॥ श्रीवृ
क्षेवांछितालक्ष्मी गर्वार्घदामकेनतु ७७ ध्वज
वज्रांकुशवज्रशंखपद्मादयस्तले॥पाणिपादेषु
दृश्यंते यस्यश्रीपतिसःपुमान् ७८ शक्तितो
मरदंडासि धनुचक्रगदोपमा॥ यस्यहस्तेभ
वेद्रेखा राजानंतंविनिर्दिशेत् ७९ द्वाभ्यांलि
यचमालायां राजामंत्रीधनीबुधः॥ एकया
यवपंक्त्याच श्रेष्ठोबहुधनोचितः ८० मणि
बंधेयवश्रेण्यास्तिस्रश्चेत्सनृपोभवेत्॥ यदि
तापाणिपृष्ठेतिततोधिकतरंफलं ८१ त्यागा
यशोणिगंभीरा सुखायमधुपिंगला॥ सूक्ष्मा
श्रियेभवेद्युक्ता सौभाग्यायसमूलका ८२
विभासपल्लवारूक्षा विषमास्थानकाह्वता॥
विवर्णास्फुटिताकृष्णा नीलाश्चन्यश्चनो
त्तमा ८३ क्लेशंसपल्लवारेखा विभावित्तस्यसं

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

शयम् ॥ कदनंपुरुषाद्रव्यविनाशविष्टमार्क
येत् ८४ मध्यमप्रांतरेखायाः प्रदेशिनीघृदा
धिका ॥ प्रचुरस्ततिपितुःपक्ष श्रियस्वाविपदो
न्यथा ८५ अनामिकांतरेखायाः कनिष्ठासा
द्यदाधिका ॥ धनवृद्धिकरीपुंसां मातृपक्षोबहु
स्तदा ८६ ऊर्ध्वरेखामणिबंधादूर्ध्वगासातुपं
चधा ॥ अंगुष्ठाश्रयणीसौख्या राज्यलाभो
थजायते ८७ राजाराजसदृशोवा तर्जनीग
तियानया ॥ मध्यमांगतयाचार्यं ख्यातो
राज्यायसैन्यपः ८८ ॥ अनामिकांप्रयान्यां
तु सोर्ध्वबाहुर्महाधनी ॥ कनिष्ठागतयास
त्या तयाश्रेष्ठोभवेद्बुधः ८९ ॥ श्लाघ्यश्श्लो
षणोरुणोस्वेदोविड्ढस्निग्धश्चमांसलः ॥ श्ल
क्ष्णस्ताम्रनखोदीर्घांगुलीकोविपुलःकरः ९०
पाणेस्तलेनशोणेन धनीनीलेनमद्यपः ॥ पीते
नागन्यनारीकःकृष्णेनचधनेप्सितः ९१ अ
रेखंबहुरेखंवा येषांपाणितलंनृणाम् ॥ तेस्फु
रत्यायुषोनिःस्वा दुःखितानात्रसंशयः ९२

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

मणिबन्धात्पितुर्लेखाकरताद्विभवायुषोः ॥ रे
खाद्वियांतितिस्रोपि तर्जन्यंगुष्ठकांतरम् ९३
येरेषाइमास्तिश्च सम्पूर्णादोषवर्जिताः ॥ ते
षांगोत्रधनायूषी सम्पूर्णानान्यथानतु ९४ग
त्वामिलतयोप्रांतेद्रव्यपित्रोश्चरेखयोः ॥ गृ
हबन्धोविनिर्देश्यो गृहभंगोन्यथापुनः ९५
आयुर्लेखाकनिष्ठांतर्लेखाःस्युर्गृहणीप्रदाः ॥
समाभिःशुभशीलास्ता विषमाभिःकुशील
का ९६ आयुलेखावसानाभिर्लेखाभिर्मणिब
न्धतः ॥ स्पष्टाभिर्भ्रातरोस्पष्टा तराभिर्जाम
यःपुनः ९७ उल्लंघ्यतेचयावंत्योंगुल्योजी
वितरेखया ॥ पंचविंशतियोज्ञेयास्तावत्यःश
रदांबुधैः ९८ मणिबन्धोन्मुखाचायुर्लेखायां
येद्रुपल्लवा ॥ सम्पदास्तेबाहियैंते विपदांगु
लिसन्मुखा ९९ यवैरंगुष्ठमध्यस्थैः विद्या
ष्णातिविभूतयः ॥ शुक्लपक्षेतथाजन्म दक्षि
णांगुष्ठगैश्चतैः १०० कृष्णपक्षेन्नृणांजन्मवा
मांगुष्ठगतैर्यवैः ॥ १ यवैरंगुष्ठमूलोत्थैस्तस्तं

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

स्यासूनवोन्नृणाम् १ अनामिकांतपर्वस्था
प्रतिरेखाप्रभुत्वकृत्॥ ऊर्ध्वापुनस्तलेतस्या
धर्मरेखायमुच्यते २ श्लिष्टान्यंगुलिम
ध्यानि द्रव्यसंचयहेतवे॥ तानिचाछिद्रयुक्ता
नित्यागशीलःततोनरः ३ एकोप्यभिमुख
स्तस्यां तपःश्रीवृद्धिकारणम्॥ सम्पूर्णो
किंपुनर्द्वौस्त पाणिमूलस्ततोन्नृणाम् ४ तु
लाग्रामममथोवज्रं करमध्येतुदृश्यते॥ वाणि
ज्यंसिद्ध्यतेतस्य पुरुषस्यनसंशयः ५ ऊर्ध्व
रेखाकारयेतु रेखास्फुरंगुलत्रयम्॥नानाभो
गसुखासीना समुद्रवचनंयथा ६ आवर्त्ता
दक्षिणाशस्तामांगुष्ठांगुलिपर्वसु॥ ताम्रास्नि
ग्धौचिषातुंग पर्वाङ्घ्रोत्थानखीशुभाम् ७
नखेंदुबिंदवःश्वेता पाण्योश्चरणयोरपि॥
अगंतवप्रशस्ताः स्युरितिभोजनृपोन्यधात्
८ त्रिकोणरेखयासीरमुशलोद्रूषलादिना॥
वस्तुनाहस्तयातेनपुरुषःस्यात्कृषीबलः ९

इति सामुद्रिकेशास्त्रे कररेखालक्षणं समाप्तम्॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

ग्रीवातिवर्त्तुलायस्य पूर्णकुम्भसमाभवे
त् ॥ पार्थिवःसतुविज्ञेयो धनधान्यसमंकु
लम् १० शंखग्रीवाप्रशंसंति शुष्कोष्ट्रग्रीवका
नतु ॥ दीर्घग्रीवावकग्रीवा शिखिग्रीवाविव
र्ज्जिता ११ ॥

इति सामुद्रिकशास्त्रे ग्रीवा लक्षणम् ॥

वृषस्कंधगजस्कंध कदलीस्तम्भमेवच ॥ म
हाभोगामहाधान्या तेसर्वेपार्थिवोपमाः १२

इति सामुद्रिकेस्कन्धलक्षणम् ॥

चंद्रबिंबोपमंवक्त्रं धर्मशीलंसदाभवेत् ॥
मृगमूषकवक्त्राश्च तेनराभाग्यवर्जिताः १३
करालवक्त्रपुरुषा धनहीनाःप्रकीर्त्तिताः ॥ ह
योवक्त्रानरायेतु दुःखदारिद्र्यभोगिनः १४ ॥

इति सामुद्रिक शास्त्रे मुखलक्षणम् ॥

यस्यमल्लोहिसंपूर्णौ पद्मपत्रसमप्रभौ ॥
भोगवान्स्त्रीप्रियश्चैवसर्वधर्मधरःस्मृतः १५
सिंहव्याघ्रगजेन्द्राणां कपोलसदृशौयदि ॥
कृषिभोगीभवेन्नित्यं बहुपुत्रःप्रजायते १६ ॥

इति सामुद्रिकशास्त्रे कपोललक्षणम् ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

रक्ताधरौनृपतिःस्यात् वक्रोष्ठौसचदुःखितः॥ स्थूलाभ्यांमधुराभ्यांच नराअत्यन्तदुःखिताः १७॥

इतिसामुद्रिकशास्त्रेओष्ठलक्षणम्॥

कुन्दपुष्पप्रतीकाशदंतैर्भूपतयःस्मृताः॥ रक्षोवानरदंताश्च नित्यंक्षुधातृषार्दिताः १८ सस्नेहैरुत्कलैर्दंतैर्दाडिमीबीजसन्निभैः॥ सुखिनःसरलाज्ञेया स्त्रीणांचवश्यकारकाः १९ दुःखितोविक्षुतैरुक्षैर्दन्तैर्मूषकसन्निभैः॥ सभाग्यामिलितैर्दंतैः विद्यावान्दंतुरैः पुनः २० द्वात्रिंशद्दशनोराजा भोगीस्यादेकहीनकः॥ त्रिंशद्दंतास्तुसुखिनः एकहीनास्तु दुःखिताः २१॥ इतिदन्तलक्षणम्॥

कृष्णजिह्वोभवेद्दासः सनरोदुःखसाधनः॥ समलायांतुजिह्वायां सभवेत्पापकारकः २२ स्थूलजिह्वास्तथाक्रूरा नराअनृतभाषिणः॥ श्वेतजिह्वानरायेतु शौचाचारविवर्जिताः २३ पद्मपत्रसमाजिह्वा भोगवान्मिष्टभो

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

जनः ॥ रक्तजिह्वाभवेद्यस्तु विद्यालक्ष्मी मवाप्नुयात् २४ ॥ इति जिह्वालक्षणम् ॥

कृष्णतालूनरायेतु भवंतिकुलनाशकाः॥ पद्मपत्रसमंतालुः सनरोभूपतिर्भवेत् २५ श्वेततालूनरायेतु धनवन्तोभवंतिते ॥ रक्त तालूनरायेतु धनभोक्तानसंशयः २६ ॥

इति सामुद्रिकेशास्त्रे तालु लक्षणं समाप्तम् ॥

हंसस्वरोनरोधन्यो मेघंचस्वरतोनृपः ॥ मृगोपमस्वरायेतु भोगवंतोनरेश्वराः २७ क्रौंचस्वरानरायेतु भाग्यवंतोभवंतिते ॥ खर काकस्वरायेतु निर्द्धनाःपापकारिणः २८ ॥

इतिसामुद्रिके स्वरलक्षणं समाप्तम् ॥

पार्थिवाःशुकनासाःस्यु दीर्घनासाश्चभो गिनः ॥ ह्रस्वनासानरायेतु धर्मशीलाश्चते विदुः २९ हस्तीनासासमायेच पीतनासा श्चयेनराः॥पीतनासाश्चयेमर्त्याःसर्वेतेजन वल्लभाः ३० स्थूलनासावक्रनासानासिका मुखमध्यगा ॥ तेसर्वेदुःखिताज्ञेया धनशील

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

विवर्जिताः ३१ ॥ इतिसामुद्रिकेनासिकालक्षणं समाप्तम् ॥

रक्ताक्षाधनवंतःस्यात् व्याघ्राक्षाश्चातको
पमाः ॥ जर्जयक्षासदादक्षा मृगाक्षाःशुभलो
चनाः ३२ बिडालहंसनेत्राये भवंतिपुरुषाध
माः ॥ मयूरनकुलाक्षाश्च सर्वेतेमध्यमाः
स्मृताः ३३ श्वानतुल्येक्षणाश्चौरा पिंगा
क्षाःक्रूरकर्मवा ॥ गवाक्षाःशुभगानित्यं केक
राक्षाद्दुराशयाः ३४ ॥ इति सामुद्रिकेचक्षुलक्षणम् ॥

ह्रस्वकर्णोमहाभोगी दीर्घकर्णश्चमध्यमः॥
रोमकर्मामनुष्याये सर्वेतेसुखभोगिनः ३५॥

इति सामुद्रिकेकर्णलक्षणम् ॥

वत्राकारंनरेंद्राणां शिरोदीर्घंतुदुःखिनाम् ॥
अधमानांघटाकारं पापीनांस्वपुटंपुनः ३६

इतिसामुद्रिकेमस्तकलक्षणम् ॥

विशेषपुनरेकोत्र भ्रुवोमध्येतुदीक्षति ॥
ऊर्णाक्षंरोमतेनाक्ष राज्यनैववशंवदेत् ३७॥

इतिसामुद्रिकेमुखलक्षणम् ॥

ललाटेचार्द्धचंद्राभे सवतेपृथिवीश्वरः॥ वि
पुलेनललाटेन अल्पायुर्जायतेनरः ३८ अ

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

ल्पेनतुललाटेन अल्पायुर्जायतेनरः ॥ उन्न
तेनललाटेन धनाढ्योभवतेनरः ३९ विषमे
नललाटेन दुःखितोजर्जरोनरः ॥ खरकर्मर
तोनित्यं प्राप्यतेवधबंधनम् ४० त्रिशूलंकु
लिशंचापि ललाटेयस्यदृश्यते ॥ ईश्वरंतंवि
जानीयात् स्त्रीवल्लभनरोभवेत् ४१ पंचभिः
शतमादिष्टं अशीतिश्चतुर्भिस्तथा ॥ भवं
तितिसृभिःषष्टि द्वाभ्यांचाविंशातिद्वयम् ४२
रेखैकेनललाटेन विंशतिःपरिकीर्त्तिता ॥
अरेखेनललाटेन विज्ञेयोपंचविंशतिः ४३ रे
खाःपंचललाटस्थाः समाःकर्णांतलोचनाः॥
भणितंयस्यगंभीरं तंविद्यात्सकलायुषम्४४
ललाटेयस्यदृश्यंते शुभरेखाचतुष्टयम् ॥
अशीत्यायुर्भवेत्तस्य पंचरेखाशतंभवेत् ४५
ललाटेयस्यदृश्येत रेखाद्वयमनागतम् ॥ ष
ष्टिवर्षविनिर्दिष्टं नारदस्यवचोयथा ४६ ल
लाटेयस्यदृश्यंते रेखात्रयमनागतम् ॥ वर्ष
विंशतिनिर्दिष्टं नारदस्यवचोयथा ४७लला

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

टेयस्यदृश्येत रेखैकाचसमायुता ॥ शतायु
स्तंविजानीयात् नारदस्यवचोयथा ४८ ॥

इतिललाटलक्षणं ॥

कुटिलैःस्फुटितैरूक्षैः स्थूलैःस्यात्तस्क
रोभवेत् ॥ दुःखिताःपुरुषाज्ञेया क्षुधाचपरि
पीडिताः ४९ विरलामधुराकेशाः स्निग्धाभ्र
मरसंनिभाः ॥ मधुवर्णाश्चयेकेशास्तेनरासु
खभाजिनः ५० नासिकानेत्रदंतौष्ठ करक
र्णाङ्घ्रिणानराः ॥ समासमेनविज्ञेया विषमा
विषमेनतु ५१ गतिस्वरास्थित्वग्मांसं नेत्रेश्रे
ष्ठेंगकेन्नृणाम् ॥ यानमाज्ञाधनंभोगसुखघोष
क्रमाद्भवेत् ५२ आवर्त्तोदक्षिणेपुंसां स्त्रीणां
वामेशुभप्रदः ॥ स्पर्शनंस्फुरणंलक्ष्म तिल
कोमशकोव्रणः ५३ ॥

इतिसामुद्रिकशास्त्रेपुरुषलक्षणाध्यायःसमाप्तः ॥

अथस्त्रीणांलक्षणानिकथ्यंते ॥

तथाविज्ञाययत्नेन शुभाशुभमतिस्थितम्
वदंतिचप्रशस्तंच स्त्रीणांवक्ष्यामिलक्षणं ५४
कीदृशीवरयेत्कन्या कीदृशीचविवर्जयेत् ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

कीदृशीकुलबालाच त्वमिदंवक्तुमर्हसि ५५
बंधुलक्षणलावण्य कुलजात्याद्यलंकृताम्॥
कन्यकांवृणुयाद्रूपवतीमभ्यंगविग्रहाम् ५६
अष्टमाद्वर्षतोयावद्वर्षमेकादशंभवेत्॥ ताच
कुमारिकालोके त्याद्यमुद्वाहमर्हति ५७ पू
र्णचंद्रमुखीकन्या बालसूर्यसमप्रभा॥ वि
शालनेत्ररक्तोष्ठी साकन्यालभतेसुखम् ५८
हस्तपादौपरीक्षेत अंगुल्यश्चनखास्तथा॥
पाणिरेखाचजंघाच कटिनाभिस्तथैवच ५९
ऊरूचोदरपृष्ठंच स्तनौकर्णौभुजौतथा॥ व
क्षस्स्थलललाटंच शिरकेशौतथैवच ६० रो
मराजीस्वरंवर्णंग्रीवानासादयस्तथा॥ ए
तत्सर्वंपरीक्षेत कन्याशास्त्रविशारदः ६१
पादौसमांगुलौस्निग्धौ भूम्यांयदिप्रतिष्ठि
तौ॥ यस्याःसुकोमलौरक्तौ साकन्यागृहमं
डिनी ६२ अंगुष्ठेनातिरक्तेन भर्त्तारंचैवम
न्यते॥ अल्पवृत्तौपतिंहन्यात बहुवृत्तौपतिव्र
ता ६३॥ इतिपादलक्षणम्॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

यस्याःस्त्रियाश्चशुभगौ लघूचविरलौपुनः॥
निर्मांसौचनिस्तेजौसाप्रियानचशोभना ६४

इति स्तनलक्षणम् ॥

ग्रीवयालम्बयाचंडी दारिद्रास्वयातया॥
कुलस्यनाशिनीनारी दीर्घयाभजतेपुनः ६५
यस्याग्रीवासुवृत्तास्यात् रेखात्रयसमन्वि
ता॥ दक्षिणावर्त्तसंकाशा सौभाग्येनाधिकं
भवेत् ६६॥

इति ग्रीवालक्षणम् ॥

रक्तजिह्वातुयानारी साभवेत्सुखभाजि
नी ॥ नित्यंवर्द्धयतेपुत्रे सुकुमारानुमोहि
नी ६७ श्वेतायांचजनेमृत्युःमलिनायांधन
क्षयः॥ श्यामायांकलहोनित्यं वंशबेदोवि
निर्दिशेत् ६८॥

इति स्त्रीणांजिह्वालक्षणम् ॥

श्वेतेनतालुनादासीदुःखिताकृष्णतालु
ना॥हरितेनचरुक्षेण रक्ततालूसुशोभना ६९

इतिस्त्रीणांतालुलक्षणम् ॥

विषमादशनायस्या विरलास्थोल्पभा

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

जिनः॥ सासंक्लेशमवाप्नोति लघुश्वेतासमा
शुभा ७०॥

इति दंतलक्षणम्॥

रोमशौचातिलंबौचयस्याओष्ठपुटौपुनः॥
विषमौचातिस्थूलौच पतिघ्नीवनिताभवे
त् ७१ यस्याओष्ठद्वयंरक्तं रोमरक्तंसमंपुनः॥
सरसंसदलंशुष्कं साभर्तुःसुखकारिणी ७२॥

इति ओष्ठलक्षणम्॥

दीर्घेणनासिकाग्रेण नारीभवतिकोपि
नी॥ ह्रस्वेनचभवेद्दासी परकर्मकरास्मृता
७३ चिप्पटानासिकायस्यावैधव्यंसाचग
च्छति॥ नातिदीर्घानाविस्तीर्णा सरलासुख
कारिणी ७४॥

इतिस्त्रीणांनासिकालक्षणम्॥

पिंगनेत्राभवेन्नारीअप्रियासाचभामिनी॥
दुःशीलासाचविज्ञेया वैधव्यंजायतेपुनः ७५
नयनेकेकरेयस्याद्दश्येतेचातिचंचले॥ कु
लयस्यापिविक्षाताानारीलक्षणभेदिभिः ७६

इतिस्त्रीणांचक्षुलक्षणम्॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

यस्यासुहसमानाया गंडेभवतिकूपिका॥ न
साभर्तुर्गृहेतिष्ठेतस्वच्छंदाकामचारिणी ७७

इतिस्त्रीणांकपोललक्षणम्॥

द्वितीयाचंद्रसंकाशंभ्रूयुग्मासमनासिका॥
रूक्षांगुलीप्रीतिकरीपत्युःसंपत्करीतथा ७८

इतिस्त्रीणांमुखलक्षणम्॥

पूर्णिमाचंद्रसंकाशं सुपुष्टंपरिमंडलम्॥
यस्यामुखंसुदीप्तंच साचलक्ष्मीरिवापरा ७९
यस्यामुखस्तथागुह्यं तथाचक्षुतथाभ्रुवौ॥
यस्याहस्तौतथापादौबाहुजंघास्तथैवच ८०

इतिस्त्रीणांमुखहस्तलक्षणम्॥

ललाटंत्र्यंगुलंयस्याःशरीरंरोमवर्जितम्॥
निर्मलंसुमहद्देहं आयुसौख्यधनप्रदम् ८१ य
स्यास्त्रीणिप्रलंबानि ललाटमुदरंसमम्॥ त्री
णिसाहन्यतेनारी देवरंश्वशुरंपतिम् ८२ ल
लाटेश्वशुरंहंति उदरेदेवरंतथा॥ भर्त्तारंचभ
गेहन्यात्साकन्यापरिवर्जयेत ८३ युग्मम्॥

इतिस्त्रीणांललाटलक्षणम्॥

स्थूलजंघापतिघ्नीस्यात दीर्घकेशा

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

धनप्रदा ॥ पुरुषैःकपिलैःक्रूरा स्कंधकेशाच
शोभना ८४ ॥

इतिस्त्रीणांकेशलक्षणम् ॥

हंसस्वराक्रौंचस्वरा नारीमधुपकोकिला ॥
चक्रवाकस्वरायासा हेमधान्यातिवर्द्धनी
८५ तीक्ष्णस्वरातिगम्भीरस्वरातिमधुरास्व
रा ॥ अष्टौसाजनयेत्पुत्रान् धनधान्यसम
न्विता ८६ ॥

इतिस्त्रीणांस्वरलक्षणम् ॥

आयातौश्रवणौयस्याः समौचसुकुमार
कौ ॥ भ्रुवौचंद्रायुधाकारौ साकन्यासुखभो
गिनी ८७॥

इतिस्त्रीणांकर्णलक्षणम् ॥

कट्यावर्तेवरानारीतल्पोवर्तेमृलान्मुजा ॥
पृष्ठावर्तेपतिघ्नीस्यात तस्मादेतंविवर्जये
त् ८८ वृत्ताप्रष्ठिस्तथाभर्त्तो यस्याभवतिनि
श्चितम् ॥ बहून्रमतेपुरुषान् दुःखितान्कुरु
तेपुनः ८९ ॥

इतिस्त्रीणांपृष्ठलक्षणम् ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

यस्यरोमाणिजंघायां मुखंचविकृतंभवेत्
रोमाभिस्तित्तिरावर्त्ति शीघ्रंभक्षयतेपतिम्
६० उद्वपिंगडकायातु वाराहखररोमका ॥
अपिराजकुलेजातादासीत्वमुपगच्छति ६१

इतिस्त्रीणांअशुभलक्षणानि ॥

यस्यास्तुहृदयेनार्यां रक्तंचतिलकंभवेत् ॥
लांबनंभवतिरक्ताभं सानारीशोभनाभवेत्
९२ लभतेवित्तसम्पन्नं पतिंचवशवर्त्तिनम् ॥
पुत्रत्रयंप्रसूतेसा तथाकन्याचतुष्टयम् ६३ स्त
नेवामेचकृष्णाभं लांबनंमशकोपमम् ॥ क्षि
प्रंवैधव्यमाप्नोति जायतेसातिदुःखिता ६४॥

इतिस्त्रीणांलांबनलक्षणानि ॥

यस्यापगमगतासो भूमिकंपःप्रजायते॥
सर्वातिवैरजननी समुद्रवचनंयथा ६५ मृद्वं
गीमृगजंघाचमृगाक्षीचमृगोदरी हंसगत्या
समानारी राजपत्नीभविष्यति ६६ कृष्णा
श्यामाचयानारी गौरीचम्पकसुप्रभा ।। स्नि
ग्धांगीस्निग्धवदना सानारीलभतेसुखम्

९७ ललाटेयस्यदृश्यंतेकृष्णंतिलकमुत्तम
म्॥ पञ्चसाजनयेत्पुत्रान्धनधान्यसमाकु
लान् ९८ यस्याश्चहसमानायललाटेस्वस्ति
कोभवेत॥ वाहनानांसहस्रस्य अधिपत्यंवि
निर्दिशेत ९९॥

इतिस्त्रीणांशुभलक्षणानि॥

पीनोरुपीनगण्डास मशतदशनापद्मप
त्रायताक्षी बिंबोष्ठीतुंगनासागजगतिगम
नादक्षिणावर्तनाभिः॥ स्निग्धांगीचारुवेषा
मृदुपृथुजघनासुस्वराचारुकेशाभर्तुःसाक्षात
तीशोभवतिचशुभगापुत्रयुक्ताचनारी २००
ऊरुस्तनौकटिकरः प्रतिमावरोमावश्वत्थप
त्रसदृशंविपुलंचगुह्यम्॥ श्रोणीललाटमुरकू
र्मसमुन्नतंच गूठोमणिश्चविपुलांश्रियमात
नोति १ पिंगाक्षी १ कूपगंडा २ परपुरुषरता
३ स्थूलजंघो ४ ध्वंकेशी ५ रुक्षाक्षी ६ वक्रना
सा ७ प्रविरलदशना ८ कृष्णताल्वोष्ठ९ जि
ह्वा १० शुष्कांगी ११ संगतभ्रू १२ कुचयुग

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

विषमा १३ वामना १४ चातिदीर्घा १५
कन्यैषावर्जनीयासुखधनरहिता दुष्टशीला
र्चनित्यम् २ ॥

इतिस्त्रीणांषोडशकुलक्षणानि ॥

यस्याःपाणितलेरेखाप्राकारस्तोरणस्तथा॥
अपिदासकुलेजाता नरेंद्रंलभतेपतिम् ३ य
स्याःकरतलेरेखा मयूरवत्रामिक्षत ॥ राजप
त्नीत्वमाप्नोति ऐश्वर्यमपिवर्द्धयेत् ४ मंड
लंपद्मचक्रंचपूर्णकुंभंचतोरणम्॥यस्याःकर
तलेबत्रं राजपत्नीत्वमाप्नुयात् ५ वृत्ताचमे
खलायस्या नाभिदेशेपिवर्तुला ॥ सास्त्रीभव
तिकल्याणं पतिंनृपतिमाप्नुयात् ६ अंत
र्भ्रुवोर्ललाटेच मशकेनरमान्विता ॥ राज्ञी
चापिकपोलेच रामेमिष्टान्नधीर्भवेत् ७ रो
मैःकनकवर्णैश्च नाभिश्चात्रिवलीवृता॥नरेंद्र
स्यवशाभार्या भवतीह्ननसंशयः ८ ॥

इतिराज्ञीलक्षणम् ॥

हृद्रोमनखकेशेषु दन्तेषुनयनेषुच॥ स्नेहो

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

नविद्यतेयासां तामताशुभकारणम् ९ अल्प
श्वदाचाल्परोमा निद्राभोजनदुर्बला ॥ गा
त्रेभ्योनचरोमाणि नारीणांलक्षणंशुभम् १०
रक्ताजिह्वामृगाक्षीच यानारीदीर्घलोचना॥
कृशोदरीगजगतिः स्त्रीणांलक्षणमुत्तमम् ११

इति स्त्रीणां उत्तम लक्षणम् ॥

पराभकूलापरयाक्रयाकिनी विवादशी
लास्वयमर्थंचोरणी ॥ आक्रंदिनीसप्तगृहप्रवे
शनी त्यजेच्चभार्यांदशपुत्रपौत्रिणी १२ अ
तिदीर्घांचह्रस्वाचअतिस्थूलाकृशातथा॥अ
तिकृष्णाचरौद्राच तादृशीवैरकारिणी १३
विकटांगुलिर्यानारी विद्रपादाश्चयाभवेत्॥
सास्त्रीवैरकारीति समुद्रस्यवचोयथा १४ कृ
ष्णजिह्वातिलंबोष्ठी पिंगाक्षीघर्घरस्वरा ॥दश
मासात्पतिंहंति साकन्यापरिवर्जयेत् १५ य
स्यातिरोमशौजंघौ रोमशौचपयोधरौ ॥ओ
ष्ठौचपरिरोमाणि शीघ्रंवैधव्यमाप्नुयात् १६
मातुलिंगौसमौहस्तौ लम्बमानंस्तनद्वयम् ॥

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

यदतेदानसंदेहो द्वितीयंकुरुतेपतिम् १७ म
हांगुलीमहानासा महासुखीमहास्तनी ॥ म
यामुखीतुयानारी सदैवदुःखिनीभवेत् १८
आवर्त्तास्त्रयोदृश्यंते ललाटेउदरेभगे ॥
लक्षयेत्साक्षणान्नूनं देवरंश्वशुरंपतिम् १९
लंबोदरीस्थूलशिरा रक्ताक्षीपिंगलोचना ॥
पतिनोपार्जितंद्रव्यमन्येनसहभक्षयेत् २०
अतिदीर्घाभृशंह्रस्वाअतिस्थूलाभृशंकृशा॥
अतिकृष्णाभृशंगौरी षडेतेदुर्भगाभगा २१
यस्यानस्पृशतिभूमिं कनिष्ठाचचतुर्थका ॥
कुमारीरमतेजारे यौवनेपिनसंशयः २२नदी
नामाचयानारी यानारीफलनामतः ॥ देवी
नामाच्चयानारीस्वयंभक्षयतेपतिम् २३तीर्थ
नामाचकन्याच साकन्याभृत्यवर्जिता ॥ वृ
क्षनामाचयाकन्या ततसुखंनावलोकयेत्
२४अदत्तावर्णयेष्ठासा लक्षणैःपरिवर्जिता ॥
नपरिणयेत्तांसाधुः समुद्रवचनंयथा २५ मा
तरंपितरंचापि भ्रातरंदेवरंपतिम् ॥ हन्या

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

त्कुलक्षणैरेभि स्तस्माल्लक्षणमिक्षते २६ ॥

इतिस्त्रीणांमध्यमलक्षणम् ॥

दक्षानुष्टाप्रियालापा पतिवित्तानुगामिनी ॥ कालौचित्याद्व्ययकरी यशोलक्ष्मीरिवापरा २७ बालाषेलकैकाले दंतैर्दिव्यफलाशनैः ॥ मोदतेयौवनस्थातु वस्त्रालंकरणादिभिः २८ हृष्येनमध्यमवया प्रौठाक्रीड़ासुकोशलैः ॥ वृद्धातुमधुरालापैर्गौरवेणतुरज्यते २९ षोड़शाब्दाभवेद् बालात्रिंशताद्भुतयौवना ॥ पंचपंचाशताद्वृद्धावृद्धास्त्रीतदनंतरम् ३० पद्मिनीचित्रिणीचैवशंखिनीहस्तिनीतथा ॥ तत्वदृष्टिविधानेनानुकुल्यास्त्रीविचक्षणैः ३१ पद्मिनीसूक्ष्मकेशाचस्वल्पकेशाचहस्तिनी ॥ शंखिनीदीर्घकेशाच वक्रकेशाचचित्रिणी ३२ वक्रस्तनौचपद्मिन्या वक्रस्तनीचहस्तिनी ॥ दीर्घस्तनौचशंखिन्याश्चित्रिणीचसमस्तनी ३३ पद्मिनीदंतशोभाच दंतोन्नताचहस्तिनी ॥ शंखिनीदीर्घदंताच स

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor

मदंताचचित्रिणी ३४ पद्मिनीपद्मगन्धाच
मधुगन्धाचहस्तिनी ॥ शंखिनीक्षारगंधाच
मद्यगन्धाचचित्रिणी ३५ हंसस्वरश्चपद्मि
न्या गूढशब्दाचहस्तिनी ॥ रूक्षशब्दाश्च
शंखिन्याःशिखीशब्दाचचित्रिणी ३६ पंक
जासनलयेनपद्मिनी वेणुदारितपदेनशंखि
नी ॥ स्कंधपादयुगलेनहस्तिनी नागरेणरम
यंतिचित्रिणी ३७ पद्मिन्यामुखसौरभ्यं
उरसौरभ्यहस्तिनी ॥ चित्रिणीकटिसौभा
ग्या पदसौभाग्यशंखिनी ३८ पद्मिनीकर
लाकेशा ऊर्ध्वकेशाचहस्तिनी ॥ चित्रिणीलं
बकेशाच दृढकेशाचशंखिनी ३९ पद्मिनी
प्रेमवांछंति द्रव्यंवांछतिहस्तिनी ॥ चित्रिणी
मानमिच्छंति कलहराचंतिशंखिनी ४० ज्ञा
तव्यंविबुधैःस्त्रीणां लक्षणंव्यापिलक्षणम् ॥ कु
लवृद्धिर्यशोवृद्धिर्लक्ष्मीवृद्धिर्भवेद्यतः ४१ ॥

इतिसामुद्रिकशास्त्रेदेहलक्षणंसमाप्तम् ॥

२. जुज १ वर्क

CC-0. Digital Donation Received and Uploaded by eGangotri on behalf of Anonymous Donor